M. T. B. COLLEGE, SURAT
Manuscripts Library

No. Ref.
Ser. 608

Title: Chalakatishtha

608

चल प्रतिष्ठा

Chāla Pratishthā	: Title
	: Author
	: Editor
	: Year, Vols.
	: Publisher
608 M.E.	: Remarks

[illegible]

श्रीगणेशायनमः॥अथजलप्रतिष्ठा॥त्रिविक्रमबोधायनादिक्रमः॥तत्रैकचोदेशेमंडपंपरिकल्प्यतदंतःप्रा
च्यामुदीच्यामीशान्यांवाकुंडंतदुत्तरतःस्नानोपकरणानिनैऋत्यांवास्नानमंडलंमध्येवेद्यांसर्वतोभद्रादिमंडलं॥
तदुत्तरतःस्वस्तिकोपरिकुंभस्थापनंचकृत्वा॥पूर्वदिनप्रतिष्ठादिनेवाअभ्यंगस्नानोत्तमवस्त्रपरिधायो
र्ध्वपुंड्रंकृत्वाचम्याकुरुसान्निध्यंदेशकालौस्मृत्वाअमुकस्ययामुत्तंर्वलाचलोवाप्रतिष्ठांकरिष्येइतिसंकल्प्य॥
तदंगतयागणेशपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राद्धंचकृत्वा॥गुरुंअष्टौचत्वारोवाऋत्विजश्च
जश्चवृत्वापूजयेत्॥ततोगुरुर्मंडपादिसर्वंप्रतिष्ठाप्य॥अग्निस्थापनंचकृत्वा॥नेवास्चरुश्रपयित्वाइतिस्था
प्य॥देवतांअन्वाधानपूर्वकंचरुंश्रपणाद्याज्यभागांतेपलाशसमिधांप्रत्येकमष्टसहस्रमष्टशतंवाप्रतिदेव
तंलोकपालमंत्रैर्वाव्याहृतिभिर्वाजुहुयात्॥तावत्संख्याकमाज्यहोमंचकृत्वास्थाप्यदेवताकमंत्रेणसमि
त्तिलाज्यानांप्रतिद्रव्यंदशदशाहुतिः॥स्विष्टकृतंकृत्वादेवतासमीपेगत्वास्थापितदेवतानांमंत्रेणअष्टस २

हस्रमष्टशतंजपेत्॥पीठोपरिदेवतास्पृशेत्॥अथयजमानोगुरवेवरंदद्यात्॥ततःगुरुर्देवंपंचगव्यैःपंचा
मृतैश्चपृथक्तत्तन्मंत्रैःशंनोदेवीतिसंस्नाव्यकलशेनचसंस्नाप्य॥श्रीखंडाद्यैरनुलेपनंउष्णोदकेनप्रक्षाल्य
पुनश्चतुर्भिःकलशैःसमुद्रज्येष्ठाइत्यादिभिःचतुर्भिर्मंत्रैणक्रमेणमभिषिच्यभद्रपीठेनिवेश्याष्टौकलशेनतोय
पूर्णान्पूर्वादिक्रमेणसंस्थाप्यसप्तमृदापल्लवान्शांत्युदकंप्रस्रवणोदकंयवान्पुष्पाणिफलानिचक्रमेण
निक्षिपेत्॥स्थापनक्रमेणकुंभैःस्नापयेत्॥तत्रमंत्राः॥आपोहिष्ठेतितृचः हिरण्यवर्णाःशुचयइतिचतुष्टयंपव
मानःसुवर्जनइत्यनुवाकश्चेति ततोवाससीपरिधायोपवीतिंदत्वागंधपुष्पधूपदीपैःसंपूज्य॥पैष्टैरष्टभिर्दीपैः
नीराज्यहिरण्यगर्भइतिहिरण्यशलाकामक्षिमंत्रंग्रहीत्वा· चित्रंदेवानामित्युद्वेनदेवनेत्रेउन्मील्यांजयित्वा
मधुनाअंजयित्वा·पुनर्मधुघृतशर्कराभिःदेवस्यत्वेत्यंजयेत्॥मंत्रांतेअनजमीतिवाक्यशेषः॥ततोभक्ष्यभो
ज्यादिआदर्शादिदर्शयेत्॥तदाग्नेकोपिनतिष्ठेत्॥ततोदर्भेष्वासीनोदर्भान्धारयमाणोपुरुषसूक्तेनस्तुत्वा·

वंशपात्रे पंचवर्णान्वितमन्नं प्रक्षिप्य देवं नीराजनं कृत्वा ॥ ॐ नमो भूताधिपतये दीप्तशूलाधराय उमापतये
सर्वविघ्नाधिपतये रुद्राय नमः ॥ शिवं अंगहितं कर्मास्तु स्वाहा इति बलिं दत्वाचामेत् ॥ ततो मंडपदेवता गंधादि
ना संपूज्य देवं तत्तल्लिंगमंत्रैः स्वाहा कर्णिकायां प्रतिष्ठाप्य गंधाद्यैः संपूज्य कुंडमंडलदेवतानाममंत्रैर्दश
दशतिलाहुतीर्हुत्वा शय्यायां देवतां पुरुषसूक्तेन नरनारायणाभ्यां ब्राह्मणैः सहोपतिष्ठेत ॥ ततो देवं पु
रुषात्मनेन नमः ॥ प्राणात्मने नमः ॥ शरीरे व्यापकं न्यसेत् ॥ प्रकृतितत्वाय नमो हृदि ॥ रसनतत्वाय नमः हस्तो ॥
गंधतत्वाय नमः पादयोः ॥ श्रोत्रतत्वाय नमः कर्णयोः ॥ त्वक्तत्वाय नमः सर्वशरीरे ॥ चक्षुस्तत्वाय नमः चक्षु
षोः ॥ जिह्वातत्वाय नमः जिह्वायां ॥ घ्राणतत्वाय नमः घ्राणे ॥ पायुतत्वाय नमः पायौ ॥ उपस्थतत्वाय नमस्यो
पस्थे ॥ पृथिवीतत्वाय नमः पादयोः ॥ आपस्तत्वाय नमः अपायने ॥ तेजस्तत्वाय नमः हृदि ॥ वायुस्तत्वाय न २
मः घ्राणे ॥ आकाशतत्वाय नमः शिरसि ॥ रजस्तत्वाय नमः ॥ तमस्तत्वाय नमः ॥ सत्वतत्वाय नमः ॥ मूर्ध्नि ॥

देवतत्वाय नमः सर्वांगे ॥ ततो पुरुषसूक्तेन न्यासं कृत्वा संपूज्याधिवासयेत् ॥ ततो मंडलस्थयोर्मध्येन गंतयः ॥
मंडलदेवतानामुपहारनिवेदनं ॥ सान्नं सर्वान्नं ब्रह्मणे ॥ घृतान्नं सोदकमिंद्राय ॥ आज्यान्नमग्नये ॥ मांसान्नं यमा
य ॥ कृष्णव्रीह्यन्नं सघृतं निर्ऋतये ॥ नवनीतोदनं वरुणाय ॥ यवोदनं वायवे ॥ हैय्यंगवं सोमाय ॥ गावो दुग्धमीशाना
य ॥ पायसं वा सर्वेभ्यः ॥ ततः शय्याप्रदेशे नैवारुं चरुं स्थापयित्वा तेन दिग्बलिं दत्वा निशायां अधिवासनं ॥ प्रातः
पुरोदयाद्देवमुत्थाप्य मूलमंत्रेणोपस्थाय ॥ घृतेन चरुं श्रपयित्वाभिघार्य मूलमंत्रेणाष्टोत्तरसहस्रमष्टशतं वा
हुत्वा घृतं तावत्संख्या हुत्वा ॥ ॐ अग्नये स्वाहा ॥ अग्नयेन्नपतये स्वाहा ॥ प्रजापतये स्वाहा ॥ विश्वेभ्यो देवेभ्यः
स्वाहा ॥ सर्वेभ्यो देवेभ्यः स्वाहा ॥ सर्वेभ्यो भूतेभ्यः स्वाहा ॥ भूर्भुवः स्वः स्वाहा ॥ अग्नये स्विष्टकृते स्वाहेति जुहु
यात् ॥ ततो यजमानः गुरवे वरं दद्यात् ॥ उदिते सूर्ये गुर्वेशान्यामेवाभिमुखं देवं कृत्वा रत्नपुष्पमूलफलौषध्या
दिदर्भापित्वा ताम्रपात्रे शांतिजलमादाय मूलमंत्रेण शतवारमभिमंत्र्य देवशिरसि आसिच्यांतिष्ठ ब्रह्मण

च.प्र. ३

स्पनइतिउपस्थाय विश्वतश्चक्षुरितिउपस्थाय देवस्यपुरस्तात्॥ ॐब्रह्मणेविष्णवेरुद्रेभ्योनमः॥ कुबेरा
यदिक्पालेभ्योवरुणायमरुद्भ्योआदित्येभ्योअश्विभ्यांमरुद्भ्योगंगादिमहानदीभ्योअग्नीषोमाभ्यां
इंद्राग्निभ्यांद्यावापृथिवीभ्यांधन्वंतरये॰ सर्वदेवायविश्वेभ्योदेवेभ्योब्रह्मणेनमइतिजप्त्वा॥ देवस्यपुर
तोयजमानमभिषिंच्य॥ देवमंत्रंजप्त्वा॥ आत्वाहार्षमितिषडृचस्यसूक्तस्य॥ ॐ आत्वाहार्षमंतरेधि॰ ध्रुव
सूक्तेनतल्लिंगमंत्रेणपुरुषसूक्तेनगायत्र्याव्याहृतिभिर्देवंप्रतिष्ठाप्यप्रतिमायांनिजवाहनायुधपरिवा
रादिकंध्यात्वापुनःपूजयित्वामुद्राप्रदर्श्यमूलमंत्रमष्टोत्तरशतंजप्त्वा॥ स्तुत्वानत्वाचम्यपरिष्टकृता
द्युपचारांगानिसमापयेत्॥ ततोयजमानंदक्षिणांदद्यात्॥ द्विजांश्चभोजयेत्॥ यथाशक्तिभूयसींद
त्वाक्षमाप्य॥ ॥कर्मेशोपंसमाप्य॥ ॥इतिशौनकोक्तचक्राचार्यादिप्रतिष्ठा॥ ॥शुभंभवतु॥ ॥सप्तो ३
पनामकभास्करेणालिखितं॥ ॥ ॥ श्रीसांबायनमः॥